# JOURNAL OF MANUSCRIPT STUDIES

Vol. XL - 2009-10

Oriental Research Institute and Manuscripts Library
University of Kerala, Kariavattom
Thiruvananthapuram-695 581

# Contents


1. Kerala Manuscripts and Indian Culture
Dr.K. Raghavan Pillai................7

2. Deterioration of Manuscripts
Dr.K.G. Sreelekha..................20

3. Critical Edition of Sanskrit Manuscripts
Dr.C.S. Sasikumar..................32

4. Obliquity, Suggestiveness, and the Exploration of the Plurisignative Potential in Ancient Chinese and Sanskrit Poetics
Dr.T. Sreedharan.................40

5. Concepts of Time and Cosmogony - the Indian Paradigm
Prof.P. Vasumathy Devi................62

7. Stuti Paddhati- Siva Stutiḥ
R. Girija.................83

8. Svalpam Vṛttavicitramarthabahulam Sastraplavam Prarabhe-Vivarṇavyakhyaya Vicintanam
Dr. Harinarayanan Mankulathillath..................115

# Stuti Paddhati- Siva Stutiḥ

**R. Girija**

Stuti or Stotra is a branch of Sahitya which is dedicated to the Gods and Goddesses. It some times deals with the main deities, other times minor gods. Siva stuti, Viṣṇu Stuti, Kṛṣṇa stuti, Subrahmanya, Ganapati ete, like wise the godesses Adi Parāśakti, Lakṣmi, Saraswati etc in a good number.

The length of the stutis are one sloka to a book itself. The present stuti is to God Siva. It extends to 225 ślokas.

It deals with the many aspects of the God Mahadeva. It is a very great poem.

The author of this Stutipadhdhati is Appaya Dikṣita. He is one among the many Poets who lived in Tanjavur, who was patronised by the Maratha King Sarabhoji.

The Stuti begins as-

ॐ नमस्ते भीमाय श्रुतिशिखर सीमाय च नमो
नमस्ते शर्वाय क्षपितयमगर्वाय च नमः।।
नमस्ते रुद्राय स्फुरदवनमुद्राय च नमो
नमस्ते साम्बाय त्रिजगदवलंबाय च नमः।।
अलिन्दसुरपादपश्रितवतान्दयातोर्ज्जुने।
पुलिन्दवपुराप्तवानघहरस्वनामाक्षरः।
मिलिन्दकचयैकयामिलितवामभागस्फुरत्
कलितनयोर्मनिर्मलगलोयमस्मत्प्रभुः।।

The ślokas having a very rich content both in verse and in vocabulary. It deals with a great variety of ślokas. The stuti Padhdhati is in the register No. 3316B. It is written in the Grantha Script. It has 400 granthas, having 25 folios and 225 ślokas. In this edition I am presenting 180 ślokas. The rest will be published in the next issue.

# शिवस्तुतिः

ॐ नमस्ते भीमाय श्रुतिशिखरसीमाय च नमो
नमस्ते शर्वाय क्षपितयमगर्वाय च नमः।
नमस्ते रुद्राय स्फुरदवनमुद्राय च नमो
नमस्ते साम्बाय त्रिजगदवलंबाय च नमः।। १

अलिन्दसुरपादपश्रितवतान्दयातोर्ज्जुने
पुलिन्दवपुराप्तवानघहरस्वनामाक्षरः।
मिलिन्दकचयैकया मिलितवामभागस्फुरत्
कलितनयोर्मिनिर्मलगलोयमस्मत्प्रभुः।। २

नैवाकारं कमपि सहते तात्विकं नो गुणं
वापार्थत्वं वा नतवकियदत्यन्ततोऽस्मत् प्रतीचः।
आम्नायानां विततिरपरिच्छेदमावेदयन्ती
त्वद्रूपस्यानघसुखचिदेकायनस्य स्मरारे। ।। ३

आत्मानन्नश्शिव परचिदानन्दरूपं भवन्तं
मन्दात्मानो वयमकुशलः पर्य्युपेतुन्तदास्ताम्।।
उच्चान्नीचानपि हि गणनादुद्धरन्तीन्दुगौरी
गौरीजानिर्ज्जयति करुण कापि ते सा गतिर्नः ।। ४

ब्रूमः किं वा पुरहर चिदानन्दरूपस्वरूपं
साम्राज्यन्नस्त्वमसि तदवभ्रंश संक्लेशितास्मः ।।
तल्लाभाय प्रतिभवति तत्त वकन्दिव्यरूपं
गौरं गौरिलसितमसितग्रीवमर्द्धेन्दुचूडम्।। ५

रूपम्मे चित्घनमनुपमं दर्शयन्त्ययागमान्ता
हन्त श्रान्तो गहनकुहनैकान्तदक्षैस्तदक्षैः।
नाप्नोम्येतैरुपहतभवत्सन्निधिश्चोपरुद्धे
नार्हस्येनं पुनरशरणं नाथ सर्वञ्जहातुम्।। ६
मान्द्यंत्वैतत् गहनकुहनैकान्तिकः क्वाक्षवर्गः
निस्तीर्णैतत् कुसृति शिव तल्लभ्यते न प्रवक्तुम्।।
दिष्ट्या तु त्वामधिगतवतो हस्तलग्ना जयश्री-
र्द्दृष्टे भानौ न खलु तमसां प्रागिव स्यात् प्रचारः ।। ७।।
रूपन्ते चित्सुखमपि शिव त्रिवच्छेदशून्या त-
ल्लीलैतत् भवति चिदचिद्वस्तुजातन्तदास्ताम्।।
नन्दामि त्वामहमनुभवन् तत्तदुत्कर्षरूप-
स्यादुत्कर्षः किमु सुखचिदुन्मेषतः कश्चिदन्यः ।। ८
अमूर्तं परं वापरं वाथ मूर्त्तं
परं वावियत्ते वपुर्यच्च नाम।
दिदेशैकत्र तत्रानिशैकाग्रताम्मे
तदभ्य र्थये त्वान्दुयस्वेनदुमौले।।९
त्वद्दिव्यमूर्त्ति परिचिन्तनधारया वा
त्वद्दिव्यनामपरिकीर्त्तनधारया वा।
कालं यथा शिव नयामि तथा दयस्व
नो चेदनेन मम किं हतजीवनेन।। १०
उच्चनीचसदसत्सुखदुः खा-
द्युच्चलद्द्विविधरूपधरः किम्।

वञ्चयस्यहह पञ्चाशरारे-
वञ्चनान्तदिह मुञ्च नमस्ते।। ११
तत्तद्रूपं वहस्ति विहरन्नेकरूपैः प्रकर्षै-
स्तांस्तां गोपायसि तदवधीस्त्वन्तदाराध्यमानः।
विश्वत्राणप्रणयि शिव ते वैभवन्तद्वराको
बोद्धुन्नेशे भवसि शरणं त्वन्ममेदन्तु जाने।। १२
स्वकरप्रतिपादित स्वचाप-
स्स्वद्रब्ज समर्चितस्वकांध्रिः।
स्वपदांस्ववतंसित स्वमूर्धा शरण-
म्मेस्तु स कोलि विश्वहेतुः।। १३
श्रीपत्युमापति पदाद्यभिधेयमूर्त्ति-
रूपन्तथा हरिहरादिमनामरूपम्।
रूपन्तवेश सुखचिद्वषोद्विरूप
न्त्वत् प्राप्तिकल्पलतिकोदयबीजभूतम् ।। १४
ज्योत्स्ना गौरं यदचलसुतजानि संवित्घनं
यन्मेघश्यामंगिरिजाकमलावल्लभं वापि रूपम्।
यद्धन्यानां भवभयहरं दर्शयन्त्याद्यवाच-
स्तत्राद्ये मे वहति कुतुकञ्चित्तमुत्तंसितेन्द्रौ।। १५
वाच्यं शिवाविति पदस्य वयं कथं वा
निर्हेतुमीदृशतया निपुणीभवामः।
यस्य स्वरूपमकृतो जनुषामशेषा-
स्सीमा गिरामविसितासितमामन्ति।। १६

मन्मूर्द्धानं सुरभयति तत्पार्वतीहस्तलाल्य-
न्त्वाद्दिव्य श्रीचरणकमलद्वन्द्वमर्द्धेन्दुमौले।
वाणी लक्ष्मीस्सरभसवशीकराधुय्या श्रुति स्त्री-
सीमन्तालंकृति विरचना तत्वारायत् परागाः।। १७
कार्त्तान्तकिंकरगणाः कृमतात्र किंवा
किं वा कृतान्त भवतोऽपि च कृत्यमत्र।
पादांबुजं भगवतो भवदीय गर्व-
सर्वस्वहारि सततं हृदि नश्चकास्ति।। १८
चूडाज्योत्स्ना लहरीभिरपाकुर्वती ध्वान्तमन्त।
स्तापं सद्यश्शमति वमति स्वैरमानन्दधाराम् ।
साम्बे तस्मिन् महसि रहसि श्रीगिरां प्राक्तनी-
स्तामंस्तापरविपरिवृत्यन्तरायोन्तरात्मा।। १९
ह्रीणात्यन्तः करणममरोदार कोटीरहीरस्मेर-
ज्योत्स्नास्नपित चरणगनीरुमाला भृतांका।
सा विश्वार्द्धं करणकरुणां बिन्दुरिन्दुप्रसन्ना
नेत्रोदन्यां हरतु हर ते दिव्यमूर्त्तिम्मदीयाम्।। २०
किं पचान इव किं विविधाशा-
लंपटोऽस्मि शिव किन्त्विदमीहे।
लुम्पतादिदमहं पदवाच्यं
त्वं परिस्फुरत्सुखं परमेशः।। २१
मघवदादिनिर्लिपन्परंपरा
मणिकिरीटमयूखमयांघ्रिणि।

मकुटकन्दलितेन्दुनिलीयता-
म्महसि मे हृदयं शितिकन्धरे।। २२
संवित्सुखपरिपाकं साम्बं कन्दर्पसुन्दरं कमपि।
शशिकलघटितचूडं शान्तं करवाण्यहं धियश्शरणम्।। २३
अर्केन्दूत्तंसितमगसुतवामवामांकसीमं
कारुण्याब्धे शिव तव चिदानन्दरूपस्वरूपम्।
स्मेरं गौरं भवजलनिधेः पारमाराद्धुमिच्छन्
तद्धीधारोल्लसितकुसुमैरर्चये सार्द्धयेदम्।। २४
उद्वेलानन्दय चिदभिधे केलिसिन्धौ कदा वा
देव्यादीव्यदीव्यन्नचलसुतया सार्द्धमर्द्धेन्दुमौले।
तद्वीचीनां प्रियसहचरैस्तापमुन्मूलयन्मे
वर्तेथास्त्वान्नयनवलनैर्वत्सलैरक्षिसीम्नि।। २५
क्रीडन्तं खल्वचलसुतया खे सुखानन्दसिन्धौ
चूडालन्त्वां शशिकलिकया द्रष्टुमभ्यागतोऽस्मि।
तत्कल्लोलैरनवधिभिराच्छादिताशेषगात्रो
न त्वामीक्षे न च शशिकलान्नाम्बिकां वा पुरारे।। २६
पापौघौघस्य हह शिव मे यद्वरा कस्य चित्ते
त्वत्पादाम्भोरुहममृतनिष्यन्दियोगीन्द्रगम्यम्।
धत्से तत्त्वं किमपि कृपयालिंगितः पारवश्यं
नीतस्सेयं जगति भगवञ्जीविका मादृशानाम्।। २७
कल्यन्मीलज्ज्वलनवलनान्यन्तरंगेऽर्पितम्मे
गौरीश त्वच्चरणमरुणं भाति कारुण्यमूर्त्ते।

सोढा ग्लानिस्त्वमसि निखिलग्लानिकारी ममैवं
क्रीतस्सोऽयं तव किमपरं तन्मदीयान्तरात्मा।। २८
कारं कारं कमपि कमपि स्वैरमालस्यतादः
खेदच्छेदि स्मरहरा! मया त्वत्पदं खल्ववाप्यम्।
भ्रामं भ्रामं क्लमभरजुषा स्तन्यमन्विच्छता
नन्वभ्येतव्यं भवति शिशुना मातुरेवोपकण्ठम्।। २९
अग्रे गौरी सकुतुक दिशत् दृक् प्रभा मेचकात्मा
शोणच्छायाधरपरिसरे चन्द्रचूडस्मितश्रीः।
ज्योत्स्नेवाभ्युल्लसति मुकुरे गण्डभागे तवास्या-
मज्जत्वस्मिन्मतिरिरिति न सुता शोणगंगा समष्टौ ।। ३०
श्रीमत्पादाम्बुजममृतनिष्यन्दिते चन्द्रचूड-
प्रेम्णा देव्यास्तदवमृशता पाणिपद्मेन साकम्।
आधत्स्वैतन्मम दृशि विभो तद्व्युपैतु ज्वरोऽस्याः
भावत्कासेचनकवपुषा पाद्यतां पारणा च।। ३२
यत्पादाब्जं हृदि विनिहितं मामके तावकीनथ
तद्धन्योऽहं त्रिभुवनगुरो भाग्यमन्यत् किमातः।
असीनो वा क्वचन विचरन्विश्वसन्नेव सत्वं
नाहं जह्यामिदमिदमुमाकान्त वाञ्छामि भूयः ।। ३२
तनुद्योतैरुद्यद्दिनकरपरार्द्धस्मरधुरा-
निरासन्तन्वद्भिर्विदधदविभिन्नं त्रिभुवनम्।
पुरो धावन्तीभिश्शत धृतिमुखाभिद्विविषदां
चमूभिस्त्वं साम्बः पुरहरपुरोऽस्याविरभवः ।। ३३

निगमलतामकुटीन्मंभासा-
मरविन्दरिपुकुलामकुटीन्नम्।
ताराजालसितानन्दासोऽहं
शिरसिजनूजालसितान्नम्।। ३४

यावद्धावयतश्श्रवस्सुखधुरालुण्डाकघण्डाकटु-
क्वाणौरन्तकसैरभस्य समुखे पातोऽस्य मैत्रस्यतः ।
तावत्तावकतुङ्गपुङ्गवखुरध्वानैर्न्निधानैर्मुदा-
न्देवाविर्भवसीष्टतूर्णमिदमायासीष्टधृष्टम्मनः ।। ३५

मन्दस्मितैर्म्मकुटकन्दलितेन्दुरेखै-
र्गौरी सखैस्फटिकगौरमनोहरांगैः।
त्वद्विग्रहैरविरतं परितः स्फुरद्भि-
श्चेतोऽस्तु मे कबलितं शिव! ते प्रसादात्।। ३६

सर्वात्मकस्त्वमसि शर्व! कयापि मूर्त्ता
तन्मे तनोषि तन्मयेऽप्यखिलाञ्च शिक्षाम्।
आवेद्मि नैष तदनुग्रहयालुतान्ते
तच्चाज्ञ एष इति तस्य दयां प्रसूताम्।। ३७

तमसः शमनं त्वदीयरूपं शर-
दिन्दुद्युति शैलजासहायम्।
नयनाद्ध्वनि नव्यचन्द्रचूडं
चरमे मे समये चकास्तु शंभो।। ३८

परिमलभराचान्ताशान्ता परिस्फुटमल्लिका
बकुलसदने मन्दप्रस्पन्दि मारुतसेविते।

सह गिरिजया नन्दन्कन्दर्पसुन्दरविग्रहो
हरतु नयनोदन्यान्धन्यात्मनां पुरशासनः।। ३९
कलाधरकलाधरे कविनिवासदत्ताकरे
नगेन्द्रतनया सखेनयनितार्कचन्द्रानले।
करात्तहरिणे स्थितिं कलय चित्त किञ्चिन्तया
दयारसधने धराधरशरासने तेजसि।। ४०
यस्मै नमः श्रुतिरियन्नति शेषितान्त्व-
द्भावग्रहे वदति लिंगतया पुरारे।
त्वन्नामपंर स्पृशतु तन्नतिशेषिते यं
लिंगं भवेन्न खलु साध्यवदन्वभामि ।। ४२
नमोऽस्तु शंकर शश्वदर्थये
समर्थयेदं करुणा निधे विभो।
दरस्मितोल्लासि मुखो हृदि स्फुरन्
दुरस्मितान्मे कुरु भस्मितामिमाम्।। ४२
करतलकलितकुरंगं करुण-
रसपूरपूरितापाङ्गम्।
कल्पितरतिपति भङ्गं कञ्चन
कलयामि कीतिर्भरतुङ्गम्।। ४३
कठोरकुचमण्डलाकलित पादपङ्केरुहः
कराग्रधृततत्करं गिरिसुतामुपर्युद्धरन्।
स्मिताञ्चितमुखांबुजस्मितमुखं पिबन्नीक्षणैः
करोतु जयमङ्गलं कनकमञ्चशायी शिवः ४४।।

निजसायकितमुकुन्दन्नीहाराचलसुताकुतुकसुकन्दम्।

किंकरदनमिषप्रदं शंकरमुपयामि सच्चिदानन्दम् ४५।।

भव तन्मयि वत्सलावुभौ

ववतन्मां पितरौ शिवौ युवाम्।

नियतं भवदेकतानतान्नय-

ताम्मामिदमस्तुवान्नमः।। ४६

ममेश तन्वन्तु मुदन्दयासुधा

झरीचयास्तावकदृग्मरीचयः।

सहासते यैर्दरहासचन्द्रिका

नमस्यदच्छेद्यतमस्यदच्छिदः।। ४७

ज्ञानानन्दोन्नति विहृतयोमूर्त्तयश्शर्वसर्वा-

स्तान्ततमाराधयति भगवन् यो यथा तन्तथा त्वम्।

ताभिः प्रोद्भासयसि भवतस्सन्निधानात् सुधी-

स्तामाराध्नोमीत्यहमिति तु यस्तस्य तासां न पारम्।। ४८

त्वं तस्कराणां पतिरिन्दुमौले

नमन्मनस्तकरताकथन्ते।

हन्ता नमो हन्त्र इति श्रुतेस्त्व-

कथन्नहन्तामदघच्छदानाम्।। ४९

मालिन्यशालिन्यपि मानसे मे

विश प्रभो ! तच्च विधेहि शुद्धम्।

दीपो गुहे किन्तिमिरोपरुद्धे

नायाति तत्किं न परिष्करोति।। ५०

प्रपन्ने सर्वस्वप्रद इति विपन्नार्त्तिह

इत्यघौघच्छिन्नामेत्यखिल तनुभाजां सुहृदिति।

यशश्शालित्वन्त्वामहमनपनोद्यार्त्तिरभिधा

पदस्ते प्राप्तोमां शिव कुधियशस्ते विदधतम्।। ५१

गिरिजास्तनभरपरिमलपिशुने शिशुनेन्दुनावतंसवति।

परिमिलतु श्रुति कबरीपरिमलगरिम्णि मनो मदीयमिदम्।। ५२

अनीक्ष्यमाणो मुखमन्यदीयमसंस्मरञ्जात्वपि चान्यधर्मम्।

अन्तस्मरन्नन्तकशासन त्वां कदा त्वदाख्यां कथयन् सुखी स्याम्।। ५३

केयं दुर्नीतिरेषा वद भवति कदा वास्ति किन्नौ विभागः

दैवादैश्वर्यमाप्तन्निरवधि भवता किन्न तत् भोक्तृता मे।।

तत्कुर्वेतन्न कुर्वित्यपि वदसि समं पश्य मामीश नो चेत्

कूटस्थे त्वान्निवेद्य स्थिरमपि भवदैश्वर्यमुन्मूलयामि।। ५४

विलसत् घनपुष्पपुष्पपुष्पं विरहस्त्री जनमारमारमारम्।

विनतामरराजराजराजं विषमाक्षं भजकालकालकालम् ।। ५५

इन्दीवरललितप्रभमिन्दु स्मयहारि वदनवारिरुहम्।

नन्दयशोदानन्दकन्दल्मापिबसुखेन सखे दृष्टे ।। ५६

शिवे यस्मिन्रज्जावहिमिव विमोहादुपनतं

गृणन्तीं वेदा जगदुदयमुद्दामरचनम्।

समुत्तुङ्ग स्थेयस्सुखसुलभतायै स भगवान्

प्रबोधानन्दात्मा जयति शिवनामात्मकतया।। ५७

अयन्ते विश्रान्तिन्निगमनिकरा यत्र परमां

यदानन्दोदन्वत् पृषत लवतुष्टा विधिमुखाः।

महेशो जिह्वायाः क्षणमपि सनैवोज्झितुमलं
ननु त्वां नामाख्ये तव मधुरतां वर्णयतु कः।। ५८
श्रीमद् गौरीरमणवपुषा श्रीशरूपेण चैकं
सत्यज्ञानामलसुखतनुस्सञ्चकास्तीश्वरोऽयम्।
तस्यैतस्याखिलजगदधिष्टानभूतस्य नाम्ना-
माम्नायोक्तिप्रविततिरियं वक्ति मुक्तिप्रदत्वम्।। ५९
जिज्ञासा हि भवत्पदे बहुजनुर्य्यज्ञादि साध्यो
दयात्वज्ञानं ननु दुर्ल्लभोऽसि सुलभो विज्ञायसे चान्यतः।
किन्नामात्र निवेदये रसनया त्वन्नाम चेत् गृह्यते
हा हन्त भ्रमणैरलं हरकरग्राहं तदा गृह्यसे।। ६०
येऽनन्यास्समुपासते स्म दुरितात् गोप्तेति चाहन्तव
त्रायस्वेति सकृत् प्रपत्तुरखिलत्रासंहराणीति च।
सत्वं प्रत्यश्रृणोर्द्दासितु भवन्नामाक्षरग्राहिणे
सर्वस्वं शिव !तावतैव जगति त्वामन्धयन्ती दया।। ६१
अप्राप्यमीक्षणमपि श्रवणं यदीयमन्यै
स्सुरर्षिभिरपीन्दुवतंसतस्याः।
मुक्तिश्रियः कबरिकास्यकराग्रलग्ना
मुग्धोऽपि यो रसनया स्पृशति त्वदाख्याम्।। ६२
जाग्रत्युमेश तव नाम्नि पुरस्फुरदौ
त्यक्त्वैतदाप्तुमनसोन्यत इष्टसिद्धीः।
क्षिप्त्वामृतं करगतं नियतं यतन्तो
भूयांसुभिर्गमयितुं प्रशमं पिपासाम्। ६३

एकैकमेव शुभमर्पयितुं क्षमाणि
हेत्वन्तराण्यपि च येन विनानुतानि।
श्रेयोऽखिलन्दिशति यत्वितरानुपेक्षं
तस्मिन् सतीश तव नव नामनि किं भयम्मे।। ६४

आत्तोऽस्मीतीरणमकरुणारोपणाय त्वयि स्यात्
दासोऽस्मीति ह्यनुपधि परित्रातृतापनवाय।
सागस्कोऽस्मीत्यपि दुराराध्यतापादकास्या-
दातस्त्वत् संस्मृतिरलमुमाकान्त गोपायितुन्नः।। ६५

महेशस्सर्वज्ञः पुरहर महादेव इति च
त्वदाख्यानामर्थं निपुणतरमासां विमृशतः।
उपास्यः कस्यान्तस्फुरति न भवानेव भुवने
गृहीतञ्चेन्नेदं हृदयमदयन्नास्तिकया।। ६६

दोषग्रहस्स्वविषये गुणधीः परत्र
सर्वत्रचेश्वरदृशः प्रिय भाषणञ्च।
त्वद्रागिता विजनवृत्तिरितीश षड्भि
स्सेवाक्रमैःकलय साधु भवत्वरम्माम्।। ६७

कैलासशिखरि धाम्नः कलिमलध्वंस हेतुनिजनाम्नः।
फणिचारुहारदाम्नः भर्त्ताप्ययमद्भुतस्य सुमहिम्नः ।। ६८

केचित्पुष्पं दलमपि जनाः क्षिप्तवन्तं प्रति त्वां
संक्रीडन्तो सुरतरुवराक्रीडसीमा सुधान्याः।
कीर्णं नीरं किमपि शिव! यैस्ते सुधासिन्धुकेलिं
स्वच्छन्दा भान्त्यपि तमभजाम्येष जाल्मो भवन्तम्।। ६९

त्वत्सुपूजास्वपि करयुगं पादयुग्मन्तथा त्वत्
प्रादक्षिण्यक्रमणविधिषु त्वत्प्रशंसासुवाचम्।
चेतस्त्वत्सं स्मृतिषु भुवि ये कुर्वते शर्व तेऽमी
धन्याः कुर्वन्त्यपि निजदृगध्वमन्यञ्च धन्यम्।। ७०
चन्द्रार्द्धशेखर भवच्चरणारविन्द सन्दर्शनादहपास्त समस्तखेदः।
आस्ताम्मदवलोकन भाजनानामप्येन सा परिभवो दुरवाप एव ।। ७१
यस्त्वत्पादाम्बुरुहकलनस्पृष्टजन्मा स मेऽस्तु
भ्राता दाता गुरुरपि सखा वानुबन्ध्वन्तरं वा।
शंभो यस्त्वय्यहह विमुखो मासमेतस्य माहं
मह्यन्द्रुह्यन्नपि भवति हित्वा श्रुतो वल्लभो मे।। ७२
प्रेयानेकस्त्वमसि परमानन्दरूपस्मरारे
प्रेयांस्ते भजन कृतिनो दृष्टमात्रात् पुनन्तः।
तच्च प्रेयस्तदुपकरणीभावमालंबते यन्नान्यत्
प्रेयस्तव हि करुणाभाजनानार्ज्जनान्नम्।। ७३
रुष्टे हरे वति गुरुर्जगतीत्यनेन
न्यायेन मां भगवतोऽन्वितमीश्वरेण।
आर्त्त्बलादवतभागवता नमो वः
कारुण्यवारिनिधयो गुरवश्च यूयम् ।। ७४
वदने शिवदिव्यनामधेयं महिमा नः पुनराशये तदीयाः।
वसतिस्सह तत्वरत्वधन्यैरति वेलं किलं भाग्यवैभवं नः। ७५
ईशेन यं प्रति सकृन्निज नामधेय
संकीर्त्तनस्य सकलाघनिवर्तकत्वम्।

साक्षादभस्यत जगद्गुरुमाश्रये
तं गोविन्द संयमिवरम्मम भागधेयम्।। ७६

आत्मा शंभो भवसि खलु न स्सच्चिदानन्दरूप
स्त्वय्येतस्मिन् किमिति न भवेज्जानतां प्रेमबन्धः।।
आत्मत्वेनाभिमतमतदित्यप्रियन्तत् प्रसंगा-
दन्यच्चेदं पदमनुपदं यत्किलोपप्लुतानाम्।। ७७

मातातातस्तवमसि भवसि त्वं हि मित्रं कलत्रं
पुत्रश्चान्य त्वमसि बत का दुर्मनीषा ममैषा।
निस्सीमार्त्ति प्रणयि तदिदं किन्न सर्वापरोक्षं
तन्मे त्वं त्वं गिरिश भगवन् सच्चिदानन्दमूर्त्ते।। ७८

आत्मानं खल्वनिदमुदयास्त्वांगिरस्संगिरन्तो
सन्त्रातारं गिरिशजगतामीशितारं वदन्त्यः।
आर्त्तश्शान्ता न्वशरणवरणस्यास्पदं कः कथं
वेत्यन्तर्ग्लानिर्म्मम पुनरसावाश्वसित्यन्तरात्मा।। ७९

भावं बध्नन्त्यकृतक गिरस्त्वय्यनन्याशयिन्यो
रागोन्मादा अपि मुनिधियो धावनैरापतन्ति।
रूपायास्मै निरुपमितये सुन्दरायेन्दुरेखा-
चूडायास्तै स्पृहयति विभावृत्तिरप्यन्तरी मे।। ८०

त्वाद्रक्षन्मे किमपि दयितं वस्तु नैवास्ति शंभो
मादृक्षास्ते शतमनुपदं त्वर्द्धनो बाधितारः।
नैकोप्यस्मिन् जगति कुमुदस्यास्ति चन्द्रायमाणो
नैतादृश्यो कति सुमनसः सन्ति चन्द्रस्य तस्य।। ८१

तद्दोषापक्षतिमुपकृतिं सव्यधादर्त्ति कृद्यः कः
कोपास्सस्तदवमृशतां तत्तु यत्किञ्चिदस्तु।
न्यक्कारस्तु स्मरहर! भवद् भक्तिभाजा कृतो
यस्सोयं त्वत् भत्त्ययमृतमधुरी भावितो रोचितो मे।। ८२
मा मे स्वप्नोप्यहह सहते यस्त्वदन्यं वदान्यं
कामं वाञ्छन्त्वितर इतरोपासनायासदैन्या।
तस्योपास्यो विधि हरिहरेष्वस्तु कोपीश सोऽपि
त्वद् भ्रूवल्लीस्फुरण शरणस्पन्दनेविन्दनेऽपि।। ८३
ब्रह्म प्रेष्ठो हर किमपरं भ्रूलता किंकरास्ते
भावत्काज्ञां भवति न बिना लभ्यसामान्यलाभः।
ऐदंपर्य्यादितरविषयादन्यथागत्यभावा-
दन्तर्यामिन्नखिलभजनश्रान्तिरन्वेतु तत्वम्।। ८४
प्राप्याणान्त्वम्महदमहदां प्रापको न्वस्वत्व।
स्सर्व प्रेत्स्यस्त्वमति सदृशं तत्तदैवोपरोधे।
तन्नाक्षेत्यन्निरुपमचिदानन्दसाम्राज्यलक्ष्मी
कांक्षिण्यस्त्वां शिव कलयते तत्वदप्यासिधन्यः।। ८५
एताद्रक्षोर्मिळविषयसत्त्क्यान्धकारान्तराला-
न्मुक्तोभक्तुप्रकरदिविषत् पादपं पादपद्मम्।।
किं भावत्कं गिरिश परमानन्दधान... नन्द
स्त्वक्ष्यत्वाधीर्नयमपि मदोक्तन्तरान्तरात्मा।। ८६
कल्याणी ते गिरिशकरुणाकल्पवल्लीमतल्ली-
गीर्वाणाग्रेसर चिरसमुत्तीषपात्रांकुरश्रीः।

दारुप्रायं परिसरगतन्तावदालंबताम्मा।
मस्या हानिर्न पुनरियता धन्यतैतस्य तु स्यात् । ८७
श्रीकान्ताद्या विबुधतिलका श्रीमतीमर्थयन्ते
यान्तो दृष्टिं स्पृहयति जनोप्येष तस्यै किलास्यै।
अप्यावृत्ता गतिरियमये नाथ तेषामतेषा
मत्यातसे समुचितमुमाकान्त मन्तुं नमन्तुम्। ८८
संवित्तत्तद्विषयविशदीकारधीरा गिरस्त्वां
व्याकुर्वाणा गुणसमुदयैल्लोभनीयाश्च तास्ताः।
श्लाघाम्याना परमपि तथा भूतये विश्वमूर्त्ते।
व्यञ्जन्ति त्वां शिवा पुनरमूस्तत्र वन्द्योऽसि च त्वम्।। ८९
मय्यत्र दोषकथनं बहुभिः किमुक्तै।
स्सिद्धार्य साधनमसत्व वचोगुणाक्तैः।
अस्मिन् वराहतिलकेप्यहहानुकम्पा-
संभासते शिव तवैव दयाम्बुराशेः ।। ९०
आप्लावनाय च निवर्त्यनिवर्त्तनाय
त्वयाश्रिते शिव न तत् किमपि प्रतीमः।
त्वं शिष्यसे पुनरखण्डसुखात्मकस्तत्
किं प्राभवा कृतधियो न जगत्यपि त्वाम्।। ९१
महिम्नामाम्नाय स्तुतिषु तव नालं पशुपते!।
तदस्मिन्नर्थेऽलन्तनितुमधरस्पन्दमपि कः।
तदत्याशामेन्तर्फलति यदयुक्त स्कुटवचो
निर्गुंभो डिंभोऽपि प्रदिशति मुदं चेतसि पितुः।। ९२

गौरीवल्लभदुर्लभस्सहि लवः कारुण्यसिन्धू-
न्मिषत्कल्लोलप्रसरैरभिन्नवपुषोमामस्पृशत्वद्दृशः।
नो चेत् क्वायमहं क्व तावदमृतस्यन्दी भृशन्दीनतो-
च्छेदी फलिग्वतरत् भवान्मम परित्रातेत्ययं प्रत्ययः।। ९३
अर्द्धोन्मीलन्नयनमसकृन्निर्गलत् बाष्पधारं
प्रादुर्भूताविरलपुलकं पर्युदस्तापवर्गम्।
वामांकालंकरण गिरिजान्दिव्यमूर्तिन्त्वदीया-
न्ध्यायन्ध्यायंप्रमुदजलधौ नाथ लीनं कदास्याम्।। ९४
साम्ब !स्वामिन् भवदनुगुणं त्वत्प्रसादेन लब्धा
त्वत्तोऽन्यस्मिन्निह विनिहिता चापलात् केवलान्नः।
शोभेते यन्न खलु भणिति सौरभास्फारभंगी-
क्रान्ताशान्ता कुणप इव हारोपिता पुष्पमाला।। ९५
त्वामाप्तानां भवति भगवन्नष्टथा वर्षभिन्ना
ग्रीवां क्ष्वेलस्थगयति शिरः किञ्च सिन्धुर्न्निरुद्धे।
एषा तावत् भवदुपकृतिं प्रक्रिया विश्रुतैव
प्रेक्षावन्तस्त्वयि तु बलवत् प्रेम बध्नन्ति चित्रम्।। ९६
या जातु स्वे पथि कथमपि प्रेक्षितन्नो जहाति
ग्लानिञ्चास्य क्षपयति भवद्वल्लभत्वञ्च धत्ते।
कल्याणी सा जपति जननी त्वत् पदांभोजभक्ति-
श्चेतश्चैतत् गिरिश तदुवष्टंभहृष्टं भवेत्किम्।। ९७
जातु भ्रूलतिकानिदेशसरणीं यान्ते समुल्लंघितुं
नालं पद्मभवो न वा हरिहरौ कुत्रेन्द्रचन्द्रादयः।

सेयं भूतिरपि त्वदीय परमैश्वर्याम्बुधेश्शीकर-
स्सौरभ्यंकियदस्य ते स्वस्यान्मैवयत्पश्यताम्।९८
न हि पतितो जीवेयं जनसंगोरघोरवाहिन्यां
त्वत्पदकमलामृतरससरसि विशन् शिव
कदा नु निर्वृणुयाम्।। ९९
शिव शिव शिव शंकरेति तारं विपिनतले विजने सदैव जल्पन्।
अविरलविगलद्दृगंबुरुधत् पुलकभरो स्तभरः कदा सुखी स्याम् ।। १००
धत्से दयाम्मनसि चेत् क्वनु तद्यश-
स्याद्यत् प्रागनेकपरिपालन संभवन्ते।
शंभो कुलालचिरनिर्मित कुंभभङ्गो
दण्डेन किन्न भवति क्षणमात्रभावम्।। १०१
आस्ते भवानस्म्यहमिन्दुमौले
दया तवास्ते मम दैन्यमस्ति।
गोप्तासि गोप्योऽस्मि किमन्यदत्र
विज्ञापनीयन्तव साम्बमूर्ते।। १०२
दयोपमन्यौ या शंभो या मृकण्डुसुते च ते।
साम्बमूर्त्ते दयामूर्त्ते मय्यार्त्ते कुरुतां दयाम्।। १०३
ध्रुवमिव कमलाधवो दयालुः
शिशुमुपमन्युमिव त्वमिन्दुमौले ।।
अव सकरुणमार्त्तमर्भक म्मां
शिव न विलम्बितुमर्हति प्रसीद।। १०४
अस्तस्पृहोऽहमभिजात दया खिलेषु

पश्यन् भवन्तमपि चैषु नमश्च कुर्वन्
ऊर्ज्जस्वलान्त्वयि रतिमुच्छ्रयितो-
पतापः क देशविचराणि तव प्रसादात्। १०५
नमो वां रोदस्यौ भवतु भवतीभ्यश्च ककुभो
नमो वाञ्चन्द्रार्कौ भवतु च नमो विश्वभवे ते।
रतिर्म्मे युष्माभिर्भगवति शिवे शैलतनया
सहाये दातव्या मयि रचयितव्या ननु दया।। १०६
दुश्चेष्टिताघपरुषेपि सुतेति बाले
माता यथाबत तया गिरिश त्वदीया।
द्वेष्ये जनेऽपि विचकासति सानुकम्पा-
पारे गिरां मधुरिमा भवदीयतायाः।। १०७
मा तावदन्तकरिपो मयि तेऽनुकम्पा
स्याच्चेदलं त्वयि सकृन्मम भावयोगः।
कीनाशकिंकर भटीरभराणां
किन्तावता न भविता सहसोपमर्द्दः।। १०८
विहाय गौरीश भवत्पदांबुजं
विहारयन् दुर्विषयेष्विदम्मनः।
जिघ्रांसुहस्ते स्वशिरः प्रयत्नतः
समर्पयन्नस्म्यसमर्थशेखरः।। १०९
कियत्पराङ्मुख्यं त्वयि सुखचिदात्मन्यहह मे
कियत्यन्यत्रैषा गतिरगतिकोपीश तदहम्।
हतात्मानुग्राह्यस्तव तु करुणानन्यशरणं

न जह्यात् कल्याणी स्वयमवगुणापह्नवगुणा।। ११०

पापीयसो मम भवेत् भवदीय सेवा
नीचस्य विप्रनिकटे स्थितिवद्दुरापा।
कालं कियन्तमिव हा मम दुर्दशेयं
केयं विभो विमुखता मयि ते प्रपन्ने।। १११

त्वद् भक्तिसंपदनुरूपगुणैरुदारै-
र्दूरोन्वितो जगति नीच इव द्विजन्द्रैः।
आ कियाच्चिरममंगलवृत्ति मे तामा-
धून्वती शिवदयामयि ते कदा स्यात्-।। ११२

भक्तिर्हित्वं शरणमितरत् तुच्छमित्यर्थतन्त्रा
बुद्धिस्सेयं प्रमितिकरणस्तोमरभपात्रम्।।
नैनामाप्नोम्यमतिरियता नन्वतप्तऽस्मि चो-
पालंभी शंभो तव सकलज्ञस्य भर्त्तुर्विनोदः। ११३

सम्राण्णि स्वादपृथगपृथक सर्ववित् गाढमूढा-
द्यानो चेद्या पुनरनुचरत् ब्रह्मशक्रादि भूतिः।
शंभो त्वम्मेशरणमिति संप्रत्यनन्यरूपान्त्वत्
भक्तिन्नाम ह ह सुलभान्नाथ नाप्नोमि धिङ्माम्।। ११४

कृतान्तविध्वंसनृशंसतास्पन्दि विक्रमस्वाप सुखास्पदांगदम्।
पदारविन्दन्तदुदारमीश ते कदानुपश्यामि मुदा न यादृशा।। ११५

लीलोपात्ता शिव तवतनुर्य्या शरच्चन्द्र-
गौरी गौरीमंकाभरणितवती चित्सुखैक स्वभावा।
चन्द्रोत्तंसा विधि हरिहरैभक्तिनम्रैरुपास्या

तस्यामस्यामचरमतनाश्चित्तवृत्तिः कुतस्स्यात्।। ११६
सोऽहन्देहेन्द्रियमुखमहादुःखसिन्धौ निमज्जा-
म्यन्तस्वात्मा हर किमपरन्तत्वतो न त्वदन्यः ।
भुङ्क्ष्वे तु त्वत्सुखचिदनघ प्राज्य साम्राज्यलक्ष्मी-
न्दूरीकुर्याम कियदिव चिरमामये वामयेऽहम्।। ११७
तवैश्वर्यं शंभो निरवधि कृपामप्यनुपधि
म्ममापदं दैन्या शरणलवशून्यन्ननुविदन्।
प्रपधेयन्नत्वामहह तदिदम्मे विमृशतः
न जाने को हेतुर्दलति शतध यं न हृदयम्।। ११८
त्वद्भक्त्यलाभदवपावकदह्यमान।
स्तामार्त्तिमप्ययि न वेद्मि तमोऽभिभूतः।
तज्जानतस्फुटमुमेश तव ह्युपेक्षा
नाथ त्वदेका गतिके मयि नानुरूपम्।। ११९
शंभो भवत् भुवनमंगलदिव्यरूपे
शान्तम्मनो यदि निषीदति निर्वृतिस्सा।
तां रुन्धतीह सकले किलदुःखरूपे
ताम्यन्ति हन्त सुखदुःखविभागमोहात्।। १२०
यत्ते रूपं त्रिनयनमुमाकान्तमर्द्धेन्दुचूडं
तन्मे हातुं क्षणमपि न सम्मन्यते नाथ चित्तम्।
तत्प्रत्यूहाविषयविषमग्रावधातार्त्तिधारा-
बाधन्ते मां तव तु करुणा स्यात् कदा वा न जाने।।१२१
आरोपितापि मम धीर्भवदंघ्रिमस्मा।

दाप्लुत्य दिव्यमणिपीठ तटाच्छुनी।
तुच्छेष्वियं पतति दोषमिमन्धयोस्या
भुङ्क्ष्वेश यश्च सुदृढां भवदंघ्रिनिष्ठाम्।। १२२
दुष्कूपगश्शवहतकोऽतिदुरासदोऽपि
किन्नु प्रसह्य दययोध्रियतेन कैश्चित्।
एवं हि मूर्खतम एष शिव प्रसह्य
पाल्यस्तवास्मि भगवन् परमानुकम्प्यः।। १२३
द्राक्षावनीननुवरैरिवमेऽवसाद-
मक्षालिरेति विषयैरियमक्ष नेतः।
अस्याश्शिवंकरममुं त्वयि भक्तियोग-
माकल्पयोर्जितमये गिरिश प्रसीद।। १२४
कालं कियन्तमहह त्वदयोगखेदः
नालं किमीश वद सोऽयमिदञ्चरम्मे।
त्वत्पादपंकेरुह किंकरवृत्तिमेका-
मुत्पादयाशु मम संक्षपयार्त्तिमेताम्।। १२५
तुच्छः किलायमिति चेद्दयसे न मे त्वं
तुच्छो न कस्तव न चेद्दयया ग्रहीतः।
न त्वद्दया यदि विना त्वयि भक्तियोगं
सोऽयं घटेत कथमीश दयां विना ते।। १२६
बन्धुक्षयादि विपदि स्थितवानतत्ज्ञः
बालो यथा शिव तथैव हसन् हसद्भिः ।
त्वद् भक्त्यलाभ परमापदिहास्म्यखिन्न-

स्त्वन्तद्विदन्मम न किन्दयसे दयाब्धे।। १२७

असूयेर्ष्यालोभ स्मरहर दुरभिमानस्मयतमः

प्रमादक्रोधादिर्मदपगुणे वर्गो निरवधिः।

कदास्मादत्तीर्णः कथय निरयादन्तकरिपो

पतेयं देव त्वत् पदकमलयोरार्त्तिहरयोः ।। १२८

अस्यन्तमात्महितमन्तिकमाश्रयन्तं

बालप्रसूः किमु न पालयतीश्वरैवम्।

जातु प्रपत्तिकलनाज्जनितानुबन्धः

हातुं हि मूर्खमपि मान्दययार्हसि त्वम्।। १२९

चिन्तयन्मम दुरात्मतां यदि

त्वन्तनोषि न दयाम्मयि श्रिते।

अन्तकान्तकगतिर्विना त्वया

अन्तकान्तकगतान्तरस्य मे।। १३०

शठो लुब्धः क्रुद्धश्चलमतिरसूयैकवसति-

जडो मूर्खस्तब्धः कुमतिरतिसन्धानरसिकः।

अघानामाकारः पुनरहमथापि स्मररिपो

दयालो देव त्वच्चरणशरणो नन्वशरणः ।। १३१

सद्रूपन्न स्मरति नहि ते शर्व !कुर्वे किमेषा

नान्तश्रान्तिन्तिरयति दुरध्यासपर्याकुलाधीः।

दोषस्तोमोन्मुषितवपुषां प्रीतिमत्प्रत्ययेन

ग्रस्ता शैव क्षपयति परिस्फूर्त्तिरस्फूर्त्ति खेदम्।। १३२

शक्नोष्यार्त्तिं क्षणमपि न न सोढुमीदृक् दया क्व
क्वैनश्चकृक्रमविरम सापेक्षता रक्षितुन्ते।
ईश क्षाम्यत्वमखिलविदस्येकमत्युच्यते
दस्सिष्णासुः किं प्रहसनपदं नोर्मिमलिन्यनृर्मौ।। १३३

अन्ते हितेपि विदिते तदनुत्सुकोऽयं
रुग्णो यथात्वयि तथावधृते शरण्ये।
हा केन वास्मि कृत एवमनुत्सुकोऽहं
हाय्यात्वयैव कृपयेश ममेयमार्त्तिः।। १३४

त्वद् भक्त्याख्यं पदमनुपमोत्तुंगमस्पष्टभंगं
वेलोल्लंघिप्रतनसुकृतश्रेणिनिश्रेणिगम्यम्।
आरोढन्द्रागहमनिपुणस्तवत् कृपापांगभङ्गी-
दाम्ना तावद्गिरिश भवतैवायमारोपणीयः ।। १३५

उन्मादयन्ति मुदितानि यदिन्द्रियाणि
खिन्नानि चेद्विपदुदन्वति मज्जयन्ति।
इत्येवमाकुलित ईश्वर नात्मनीने
दक्षोऽस्म्यनन्यशरणश्शरणं गतस्त्वाम्।। १३६

त्वत्पादपद्म विमुखस्य दुरात्मनो मे
दाहोऽन्यविषयसक्ति दवानलेन।
अर्हस्स एष हर किन्तु दयाम्बुधे!
मद्दौरात्म्यहान्यकरणं तव नानुरूपम्।। १३७

अजिघ्रतार्थान्तरमाशयेन
श्रीशंभुचिन्तामृतशीतलेन।

स्यां किं सुखी तिष्ठतु तत् ब्रुवे किं
मनोरथोऽप्येष सुदुर्ल्लभो मे।। १३८
त्वद् भक्त्यलाभविपदार्त्ति निदह्यमान-
स्सा हन्तदार्त्तिमनलेन विदह्यमानः।
वृक्षस्तदार्त्तिमिवनालमुपैतु मे
तन्मद्दौस्थ्यमीश तव किन्न दयां प्रसूते।। १३९
सभा हृद्याविद्यानिरुपहतयो भूतिततयो
गुणोदारादारा इतिह विषयेष्वप्यरतिः।
अमुन्तावद्धावत्यमृतरसनिष्यन्दिनि विभो
न यावत् भावत्के हरचरणपद्मे परिचयः।। १४०
हितार्थी नन्वस्यादिशसि सुखसिन्धौ त्वयि रतिं
विपत्युद्गारिभ्यो विषयविसरेभ्यश्चविरतिम्।
दयान्ते सोपाधिं नियतमिहताहन्निगमया,
म्यहो मूर्खः पाल्याश्शिव तव कृपालोरुपनतः।। १४१
आत्मानन्त्वान्निरवधि सुखांभोनिधिं पर्युदस्य
न्नात्रत्यैतेष्विति विसदृशेष्वदमश्शीकराणून्।
शंभो मज्जन्नयमनलमातोपहास्यः
क्रीडापात्रं मिलिति नोद्धरस्यञ्जसा माम्।। १४२
जगति न ममागसां गणैः करुणाब्धे किमिति प्रकुत्यसे।
रुषमुद्वहते पदाहतैर्गुरुरुत्संगगतस्य किं शिशोः।। १४३
न कुतोदयते विभो भवानपराधाननुचिन्तयन्मम।
प्रहरन्नपि किन्न फल्गुनो भवतारक्षि दयापयोनिधे ।। १४४

अपराधिषु नैव मे समः क्षमया गोप्तृषु नैव ते समः।
तदुपैषि किमित्युदासि कामनुकम्पांकुरु शंकरप्रभो।। १४५
सदसच्च जनस्समन्तनोत्यनुशिष्टो भवतात्मना।
अपराधकथा कथन्नु तन्मयि कारुण्यनिधे महेशितुः।।१४६
भगवन्विरला गुणा नृणामपराधास्तु शतं पदे पदे।
यदि पालनकीर्त्तिकामना भवतस्तत्भवतूत्तरादरः ।। १४७
सकलज्ञविभो विपद्द्रुतं किमु गोप्ता यदि किंकन्नमसि।
नहि दुष्पथगामिनं नृपशुं पशुनाथः प्रतियन्नुपेक्षते । १४८
परावज्ञानिष्ठः परुषवचनानां प्रसवभूः
स्वदोषाणां गोप्ता स्वरसगतिरेनस्त्वहमिदम्।
करालं हि ध्वान्तं कथमिव तराणीश्वर कदा
चराणिस्वैरन्त्वच्चरणनखचन्द्रप्रमुदितः ।। १४९
अपराधोदधिरूर्ज्जिता भवत्यपितनपन्नराधमप्यहेम्
करुणाकर शंकर त्वया परिपाल्यो यमतोऽनुबन्धतः।। १५०
त्वच्चिन्तनादिषु तदुत्थ सुखे च नाहं
योग्योऽस्मि तत्तदनुचिन्तन चान्तरायाः।
हा क्रन्दनेऽपि कति मे मयि तेऽनुरूपा
नाथ त्वदेकगतिके किमिवात्युपेक्षा।। १५१
अपि मनुष्यजनुष्यजनीह चेन्मम
न शंकर किंकरता सुखम्।
अहह कं प्रति किं प्रतिपादये
मम हि पंकमशंकमना कुशम्।। १५२

प्रियमप्रियमप्रियं प्रियं बिदधत्या भवदीय मायया।
परमार्थगतिर्दवीयसी क्रियतें नाथ कृपा कदास्तु ते।। १५३
शंभों पदाब्जकटकं तव योधीशतें
देवस्य तस्य चरणांबुदयांबुधे त्वम्।
मौलौ वहन् प्रथयसि श्रिवत्सलत्वं
तत्त्वामसावहमहो न भजामि धिङ्माम्।। १५४
त्वत्पादपद्म रसिकेष्वहमप्युमेश
कश्चित् भवेयमितिमेऽनुचितापि कांक्षा।
एन्द्रे पदे शुन इवेयमहो भृशम्मा-
मन्तस्तुदत्यहति शिव किंकरोमि।। १५५
गास्त्रातवान् सखि तयादृतवान् कपींस्त्वं
भूषात्मनाहिचयमाप्ततया पिशाचान्।
गृह्णास्यमीषु यदि मामपि कञ्चिदीश
हा हानिरस्य भवतः कृपया तु भाव्यम्।। १५६
भवत्पदांबुजे भक्ति भवरोग विनाशिनीम्
देहि मे पाहि मां शंभों देव देव दयानिधे।। १५७
अविवेक विधिर्निराश्रयो न रुषान्तें पदन्दयस्व मे।
कथय द्रुहिणास्त्रभाजनं भुवने किं कलविं कपोतकः।। १५८
अतिसंहत एष दस्युभिस्सुचिरादन्तरवस्थितैः प्रभो।
किमिवाकरवं न वेद्मि तन्मयि मन्तुं नहि मनतुमर्हसि।। १५९
विषयाभिनिवेशदुर्विषलपितन्दुःसहमोहरूषितम्।
शिव !मास्म भवानुदास्त मां परिपुष्णातु दया सुधारसैः ।। १६०

उद्यत्कृतान्तसविधोऽस्मि पदे पदेऽहं
वध्यो वधस्थलमिव प्रतिनीयमानः।
त्वामन्तकान्तकान्तकमसौ न भजामि
धिङ् मामस्मीश ते किमपरं प्रसभानुकम्प्यः।। १६१
रुन्धन्ति ते मामिह षडंबुधयः स्मराद्याः
पारं परन्त्वमधिगत्य विभासि चैषाम्।।
साम्ब प्रभो भवदपांगलवप्लवे सत्येतां
स्तराणि विहराणि च सन्निधौ ते।। १६२
देहात्मताख्य नरके स्थितमेतदुत्थ
श्रेयस्तदन्यसमवाप्त्यपनोदनिष्टम्।
दावानलस्थमदसीयसुगन्धी धूम
धूमान्तराप्तिविगमाभिरताप्रतीमः १६३।।
अहम्मे हन्ताहन्तव कितववृत्या विषभरं
किरन्त्या दूनस्स्यां कियदिव चिरं वीतशरणः।
प्रसीदातश्शातकृतवमपि वा वैधसमपि
त्वयास्माकम्मा भूत्पदमपि भवान्यै नम इदम्।। १६४
त्रैगणिताखिलजगतामपि करकलितत्रयी रहस्यानाम्।
श्लाघावारवधूटीघटदासत्वन्तु दुर्निरासम्।। १६५
संविल्लेशद्रविणकणिकासन्निकर्षप्रसूतै-
र्दर्पैः क्रान्ता विधि हरिमुखोदासिकान्दैशिकैर्ये।
त्वय्यत्येषां शिव न गणना का कथाऽन्येषु तेषां
दुस्साध्यो हि त्वमसि शरणं मादृशानां कृशानाम्।। १६६

क्व वा शम सुधोर्मिलां क्व वा परमार्थधी निश्चलाः
कदा ननु भजेम तानिति परिभ्रमामो वयम्।
निमित्तलवनिस्पृहानवधिकोपधूपायि-
तानुपासितुमपासितुं बत वृथा वयोनेष्यहो।। १६७
आरोपयदभिरपरम्महिमानमन्यै।
राकृष्टधीरननुसन्दधदात्मनैच्यम्।
नष्टोऽस्मि दुष्टदुरहंक्रियया हतस्त्वां
नैवा स्मरं शिव कथम्मयि ते दया स्यात्।। १६८
वेद्यं न किञ्चिदपि वेद्म्यखिलज्ञताभि-
मानस्तु मेऽनवधिरीश न चात्मनीनम्।
कुर्वे किमप्यथ महान् कृतकृत्यताभि।
मानः कथन्नु मयि मूर्खतमे दयेथाः।। १६९
परमथने पुरमथने ये स्मृतेन्यकामिन्या
कामनयाकामनयानामनया वेत्यया श्रियं यां याम्।। १७०
प्रपन्नन्नागोप्तुं प्रभवसि महेशोऽपि जगतां
शिव त्वं सर्वज्ञो न तदवगुणान्वेदितुमलम्।
प्रपत्तिश्च त्राता त्वमिति धिषणात्वां हि करुणा-
नियच्छत्येवन्तन्ममतरणतर्कोपकरणम्।। १७१
साम्राज्यं वा करकलितमस्त्यस्तुवाकिञ्चनत्वम्
सार्वज्ञं वा भवतु भवतून्मस्तकं वापि मौढ्यम्।
एतत्त्वीहे कुरु शिव !कृपाम्मे तु माच प्रहासीदेकः
क्षेमं करकुलगुरुः मां भवत् भक्तियोगः।। १७२

य क्वा हित्वा स्फुरति यदपि त्वां विनाहंसमस्मि
प्रत्येतुन्तत् गिरिश न मया वार्यते नापरैर्वा।
संगोप्ता मे सकलविधया जागरूकस्समन्ता-
देवन्तावत् भवसि भगवान् तद्भयस्योद्भवः कः।। १७३

यदात्मनीनं तदवेत्य वाञ्छितुं न
हि क्षमोस्मीति तदप्यवाञ्छितम्।
विमूढमेतादृशमिन्दुचूड मां
यदीशिषे गोप्तुमये तदीशिषे।। १७४

सद्वासद्वाप्यकृतमकृतं यत्कृतन्तत्कृतन्तत्
खेदम्मोदन्न पुनरुपयात्यन्तरात्मा स एषः।
ज्ञातन्तत्वं शिव तव कृपाविग्रहाद्देशिकेन्द्रात्
प्रारब्धन्तत् क्षपयितुमसावस्ति कालं प्रतीक्षन्।। १७५

निधिं निरवधिं यदाप्यवधि चन्द्रचूडाभिधं
सुखन्न खलु मन्यसेऽलसतयात्र हा हन्यस्ते।
अवस्तुनि सुखानुकारिणि विपत्गणोद्गारिणि
प्रधावसि प्रधावसीदसिकिमर्थमित्थं मनः । १७६

अन्यस्य दृष्टिसरणावपतन् स्वदोष-
चिन्ताभूशान्तदुरहंकृतिचण्डतापः।
तस्मिन् भवद्गुणवितत्यमृतांबुराशौ
मज्जन् कदा मदनसूदनि निर्वृतस्याम्।। १७७

दुःखानि खलु दिशन् दुरितप्रवृत्ति-
भङ्गादर्शयसि भर्गा दयाम्बुधे त्वम्।

पुत्रे पितेव शुभबुद्धिकृते प्रहर्त्ता
तनैष वेद्मि कुमतिस्तदये दयेथाः।। १७८
तुष्टिन्तु कोऽपि मयि दोषमुदाहरन्त-
सन्तं वदन्ति यदि चेत्सहितोपदेशः।
चेदन्यथा पुनरयं भ्रमजः प्रलापः
कौतूहलाय घटते किमितीह कोपः।। १७९

GIRIJA.R
Associate Professor,
ORI & Mss. Library,
University of Kerala,
Kariavattom.